5

CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library

S.D.P.B.
Coll. No. 520

Title Dasa Maha vidhya Krama

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 520 Subject:

Title: Dasa Mahā vidhyā krama

Author: — Scribe: Krisna deva

Date of the work: — Date of the Ms.: V.S. 8502

Place of the work: — Place of the Ms.:

Size: 7.7" by 4.5" Extent: 9 foll. (1-2 missing)

Language: Sanskrit Script: Devanāgarī

Remarks: Begins abruptly.

[illegible] ॥ क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं
क्रीं हूं हूं ह्रीं ह्रीं स्वाहा ॥ २२ इति द्वाविंशत्यक्षरां मूलमंत्रं यथा
शक्ति जपेत् ॥ पुरश्चर एवं वर्ण २ लक्षंजप ॥ लक्षंजप प्रसिवा ॥
॥ ॥ इति दक्षिणकाली ॥ ॥ अथ महोग्रतारा ॥ तत्र महो
ग्रतारामंत्रो द्वितीयं ॥ ॐ ह्रीं स्त्रीं हूं फट् द्वयं पंचाक्षरी महोग्र
तारा ॥ ह्रीं स्त्रीं हूं फट् प्रणवरहिता चतुरक्षरी एकजटा ॥
ह्रीं स्त्रीं हूं प्रणवास्त्ररहिता त्र्यक्षरी नीलसरस्वती ॥ ॐ अ
स्य श्रीमहोग्रतारामंत्रस्य अक्षोभ्य ऋषिः ॥ बृहती छंदः
श्रीमहोग्रतारा देवता ॥ ह्रीं बीजं ॥ हूं शक्तिः स्त्रीं कीलकं ॥
मम चतुर्विधपुरुषार्थसिद्धये जपे विनियोगः ॥ इति संकल्प ॥

अक्षोभ्याय ऋषये नमः ॥ शिरसि ॥ बृहती छंदसे नमः मुखे ॥
श्रीमहोग्रताराये नमः हृदये ॥ ह्रीं बीजाय नमः गुह्ये ॥ हुं शक्ति
ये नमः पादयोः ॥ स्त्रीं कीलकाय नमः सर्वांगे ॥ ॐ ह्रां अंगुष्ठाभ्यां
नमः ॥ ॐ ह्रीं तर्जनीभ्यां नमः ॥ ॐ ह्रूं मध्यमाभ्यां नमः ॥ ॐ ह्रैं अना
मिकाभ्यां नमः ॥ ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ॐ ह्रः करतलकर
पृष्ठाभ्यां नमः ॥ इत्यंगुष्ठादिन्यासः ॥ ॐ ह्रां हृदयाय नमः ॥ ॐ ह्रीं
शिरसे स्वाहा ॥ ॐ ह्रूं शिखायै वषट् ॥ ॐ ह्रैं कवचाय हुं ॥ ह्रौं
नेत्रत्रयाय वौषट् ॥ ह्रः अस्त्राय फट् ॥ इति हृदयादिन्यासः ॥ अ
थ ध्यानं ॥ विश्वव्यापकवारिमध्यविलसच्छ्वेताम्बुजन्म
स्थितां कर्त्रीं खड्ग कपाल नील नलिनै राजत्करां नीलभां ॥ 3
कांचीकुंडलहारकंकणलसत्केयूरमंजीरतामाप्तैर्नागवरैर्वि

भूषिततनुमारक्तनेत्रत्रयां ॥ पिंगोग्रैकजटां लसत्सुरसनां
दंष्ट्राकरालाननां व्याघ्रत्वक्परिधानशोभितकटिं श्वेतास्थिप
ट्टालिकां ॥ अक्षोभ्येण विराजमानशिरसं स्मेराननांभोरुहां ता
रां शावहृदासनां दृढकुचामंबां त्रिलोक्याः स्मरेदिति ध्यात्वा
मनसा संपूज्य यथाशक्ति जपेत् ॥ पंचलक्षपुरश्चरणं ॥
विस्तरस्तु श्री ग्रंथांतरे द्रष्टव्यः ॥ २ ॥ षोडशपात्रादिकं गुरुमुखाद्वेदि
तव्यानि नेह प्रपंच्यते ॥ ३ ॥ अथ भुवनेश्वरी ॥ ॐ अस्य श्री भुवने
श्वरीमंत्रस्य शक्ति ऋषिः ॥ गायत्री छंदः ॥ श्रीभुवनेश्वरी देवता ॥
हं बीजं ॥ ईं शक्तिः ॥ रं कीलकं मम श्रीभुवनेश्वरी प्रसादसिद्ध्यर्थे
जपे विनियोगः ॥ ४ ॥ इति संकल्प ॥ ॐ शक्ति ऋषये नमः शिरसि ॥
गायत्री छंदसे नमः मुखे ॥ श्रीभुवनेश्वर्यै देवतायै नमः ॥ हृदये ॥

ह्रं बीजाय नमः गुह्ये॥ ह्रं शक्तये नमः पादयोः॥ ह्रं कीलकाय नमः
सर्वांगे॥ इत्यृष्यादिन्यासः॥ ह्रां अंगुष्ठाभ्यां नमः॥ ह्रीं तर्जनीभ्यां नमः॥
ह्रूं मध्यमाभ्यां॰ ह्रैं अनामिकाभ्यां॰ ह्रौं कनिष्ठिकाभ्यां॰ ह्रः करतल
करपृष्ठाभ्यां॰ ह्रां हृदयाय॰ ह्रीं शिरसे स्वाहा॥ ह्रूं शिखायै॰ ह्रैं क
वचाय॰॥ ह्रौं नेत्रत्रयाय॰ ह्रः अस्त्राय फट्॥ इति करांगन्यासः॥
मूलेन सप्तधा त्रिधा वा व्यापकं न्यासं कृत्वा ध्यायेत्॥ यथा॥ उद्य
द्दिनकरद्युतिमिंदुकिरीटां तुंगकुचां नयनत्रययुक्तां॥ स्मेरमु
खीं वरदांकुशपाशाभीतिकरां प्रभजे भुवनेशीं॥ इति ध्यात्वा॥
मनसा संपूज्य॥ ह्रीमित्येकाक्षरं जपेत्॥ द्वात्रिंशल्लक्षजपः॥
पुरश्चरणे॥ ४॥ अथ त्रिपुरभैरवी॥ ॐ अस्य श्रीत्रिपुरभैरवीमंत्रस्य
दक्षिणामूर्तिर्ऋषिः॥ पंक्तिश्छंदः श्रीत्रिपुरभैरवी देवता॥ ह्सैं बीजं॥ ४

ह्सौं शक्तिः ह्स्क्ल्रीं कीलकं मम निर्विघ्नपुरुषार्थसिद्ध्यर्थे जपे विनि
योगः॥ इति संकल्प्य॥ ॐ दक्षिणामूर्तिऋषये नमः शिरसि॥ पंक्ति
श्छंदसे नमः मुखे॥ श्रीत्रिपुरभैरवीदेवतायै नमः हृदये॥ ह्सैं बीजाय
नमः गुह्ये॥ ह्सौः शक्तये नमः पादयोः॥ ह्स्क्ल्रीं कीलकाय नमः सर्वांगे॥
इति ऋष्यादिन्यासः॥ ॐ ह्स्रां अंगुष्ठाभ्यां॰ ॐ ह्स्रीं तर्जनीभ्यां॰ ॐ ह्स्रूं
मध्यमाभ्यां॰॥ ॐ ह्स्रैं अनामिकाभ्यां॰ ॐ ह्स्रौं कनिष्ठिकाभ्यां॰ ॐ ह्स्रः
करतलकरपृष्ठाभ्यां॰॥ ॐ ह्स्रां हृदयाय॰ ॐ ह्स्रीं शिरसे स्वाहा॥
ॐ ह्स्रूं शिखायै॰ ॐ ह्स्रैं कवचाय हुं॥ ॐ ह्स्रौं नेत्रत्रयाय वौषट्॥ ॐ
ह्स्रः अस्त्राय फट्॥ अथ ध्यानं॥ उद्यद्भानुसहस्रकांतिमरुण
क्षौमां शिरोमालिकां रक्तालिप्तपयोधरां जपवटीं विद्यामभीतिं
वरं॥ हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्वक्त्रारविंदश्रियं देवीं बद्धहि

मांश्रुरत्नमुकुटां बद्धेन्दुबिंदुच्छिन्नां इति ध्यात्वा मनसा संपूज्य ॥
क्लैं हूं क्रों ह्रौं इति मूलमंत्रं यथाशक्ति जपेत् ॥ द्वादशलक्षजप:
पुरश्चरणं ॥ होमस्तु द्वादशांशतस्त्वमिति विशेष: ॥ ५ ॥ अथ
छिन्नमस्ता महाविद्या ॥ ॐ अस्य श्रीप्रचंडचंडिकाछिन्नमस्ता
मंत्रस्य भैरवऋषि: सम्राट् छंद: श्रीप्रचंडचंडिकाछिन्नमस्तादेवता ॥
ह्रीं बीजं स्वाहा शक्ति: मम सकलपुरुषार्थसिद्धये जपे विनियोग: ॥
इति संकल्प्य ॥ भैरवऋषये नम: शिरसि ॥ सम्राट् छंदसे नम: मुखे ॥
श्रीप्रचंडचंडिकाछिन्नमस्तादेवतायै नम: ॥ हृदये ॥ ह्रीं बीजाय नम: गुह्ये ॥
स्वाहाशक्तये नम: पादयो: ॥ इति ऋष्यादिन्यास: ॥ ॐ आं खड्गाय
कनिष्ठिकाभ्यां स्वाहा ॥ ॐ ईं सुखड्गाय अनामिकाभ्यां स्वाहा ॥ ॐ ऊं
श्रीं वज्राय मध्यमाभ्यां स्वाहा ॥ ॐ ऐं पाशाय तर्जनीभ्यां स्वाहा ॥ ॐ औं
अंकुशाय अंगुष्ठाभ्यां स्वाहा ॥ ॐ अ: सुरक्ष सुरक्षयाय करतलकरपृष्ठा ५

भ्यां अस्त्राय फट् स्वाहा ॥ इत्यंगुष्ठादिन्यास: ॥ ॐ आं खड्गाय हृदयाय स्वाहा ॥
ॐ ईं सुखड्गाय शिरसे स्वाहा ॥ ॐ ऊं श्रीं वज्राय शिखायै स्वाहा ॥ ॐ ऐं
पाशाय कवचाय स्वाहा ॥ ॐ औं अंकुशाय नेत्रत्रयाय स्वाहा ॥ ॐ अ:
सुरक्ष सुरक्षयाय अस्त्राय फट् स्वाहा इति षडंगन्यास: ॥ अथ ध्यानं ॥
भास्वन्मंडलमध्यगां निजशिरश्छिन्नं विकीर्णालिकं स्फारास्यं प्रपि
बद्गलत्स्वरुधिरं वामे करे बिभ्रतीं ॥ याभासक्तरतिस्मरोपरि
गतां सख्यौ निजे डाकिनीवर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्न
मस्तां भजे ॥ इति ध्यात्वा मनसा संपूज्य ॥ ॐ श्रीं ह्रीं ह्रीं ऐं वज्रवैरोचनी
ये ह्रीं ह्रीं फट् स्वाहा ॥ इति सप्तदशार्णं मंत्रं यथाशक्ति जपेत् ॥ चतु
र्लक्षजप: पुरश्चरणं ॥ ॐ अस्य श्रीधूमावतीमंत्रस्य पिप्पलादऋषि: ॥
निचृच्छंद: ॥ ज्येष्ठा धूमावती देवता ॥ धूं बीजं स्वाहा शक्ति: शत्रुपराज
येजपे विनियोग: इति संकल्प्य ॥ ॐ पिप्पलादऋषये नम: शिरसि ॥
निचृच्छंदसे नम: मुखे ॥ श्रीधूमावतीदेवतायै नम: हृदये ॥ धूं बीजाय

नमः गुह्ये ॥ स्वाहा शक्तये नमः पादयोः ॥ इति ऋष्यादिन्यासः ॥ ॐ धूं धूं
धूं अंगुष्ठाभ्यां नमः ॥ धूं मां धूं तर्जनीभ्यां नमः ॥ धूं वं धूं मध्यमाभ्यां
नमः ॥ धुं तिं धुं अनामिकाभ्यां नमः ॥ धूं स्वां धूं कनिष्ठिकाभ्यां नमः ॥
धूं हां धूं करतलकरपृष्ठाभ्यां नमः ॥ धूं धूं धूं हृदयाय नमः ॥ धूं मां
धूं शिरसे स्वाहा ॥ धूं वं धूं शिखायै वषट् ॥ धुं तिं धूं कवचाय हुं ॥
धूं स्वां धूं नेत्रत्रयाय वौषट् ॥ धूं हां धूं अस्त्राय फट् ॥ इति हृदयादि
न्यासः ॥ अथ ध्यानं ॥ श्मशानसंस्थितो ध्यायेज्ज्येष्ठां वायससंस्थि
तां ॥ अत्युच्चा मलिनांबरा खिलजनोद्वेगावहा दुर्मना रूक्षाक्षि
त्रितया विशालदशना सूर्योदरी चंचला ॥ प्रस्वेदांबुचिताक्षुधा
कुलतनुः कृष्णातिरूक्षप्रभा ध्येया मुक्तकचा सदा प्रियकलि
धूमावती मंत्रिणा ॥ इति ध्यात्वा मनसा संपूज्य ॥ ॐ धूं धूं धूमा
वति स्वाहा ॥ इति मंत्रं यथाशक्तिं जपेत् ॥ लक्षजपः पुरश्चरणं ॥ ६
संख्या

॥ अथ बगलामुखी ॥ ॐ अस्य श्रीबगलामुखी
मंत्रस्य नारद ऋषिः ॥ बृहती छंदः ॥ श्रीबगलामुखी पीतांब
रा देवता ॥ ह्लीं बीजं स्वाहा शक्तिः ॥ मम निखिल मनोरथ सिद्ध
ये जपे विनियोगः ॥ इति संकल्प ॥ नारद ऋषये नमः शिरसि ॥
बृहत्यै छंदसे नमः मुखे ॥ श्रीबगलामुखी पीतांबरा देवतायै नमः
हृदये ॥ ह्लीं बीजाय नमः ॥ गुह्ये ॥ स्वाहा शक्तये नमः पादयोः ॥
नमः सर्वांगे ॥ इति ऋष्यादिन्यासः ॥ ॐ ह्लीं अंगुष्ठाभ्यां नमः ॥
बगलामुखी तर्जनीभ्यां ० सर्वदुष्टानां मध्यमाभ्यां ० वाचं मुखं पदं स्तंभ
य अनामिकाभ्यां नमः ॥ जिह्वां कीलय कनिष्ठिकाभ्यां ० बुद्धिं विनाश
य ह्लीं ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ ॐ ह्लीं हृदयाय ० बगला
मुखी शिरसे स्वाहा ॥ सर्वदुष्टानां शिखायै वषट् ॥ वाचं मुखं पदं

स्तंभय कवचाय हुं ॥ जिह्वां कीलय नेत्रत्रयाय वौषट् ॥ बुद्धिं वि
नाशय ह्लीं ॐ स्वाहा अस्त्राय फट् ॥ इति षडंगन्यासः ॥ अथ ध्यानं ॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभांग
रुचिं शशांकमुकुटां सच्चंपकस्रग्युताम् ॥ हस्तैर्मुद्गरपाशवज्र
रसनाः संबिभ्रतीं भूषणैर्व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तं
भिनीं चिंतयेत् ॥ इति ध्यात्वा मानसैरुपचारैः संपूज्य ॥ ॐ ह्लीं
बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तंभय जिह्वां कीलय
बुद्धिं विनाशय ह्लीं ॐ स्वाहा ॥ इति षट्त्रिंशदक्षरं मंत्रं जपेत् ॥
षट्त्रिंशल्लक्षजपः पुरश्चरणं ॥ लक्षजपः पूर्वसेवा ॥ ८ ॥ अथ
मातंगीविद्या ॥ ॐ अस्य श्रीराजमातंगीमंत्रस्य मतंगऋषिः ॥ ८
अनुष्टुप् छंदः ॥ श्रीमातंगेश्वरी देवता क्लीं बीजं स्वाहा शक्तिः ॥

मम निखिलमनोरथसिद्धये जपे विनियोगः ॥ ऋष्यादिन्यासः ॥
ॐ मतंगऋषये नमः शिरसि ॥ अनुष्टुप्छंदसे नमः मुखे ॥ श्रीमा
तंगेश्वरीदेवतायै नमः हृदये क्लीं बीजाय गुह्ये स्वाहा शक्तये
पादयोः ॥ मूलं सर्वांगे ॥ इति ऋष्यादिन्यासः ॥ ॐ ह्रीं ऐं श्रीं अंगु
ष्ठाभ्यां ० नमो भगवति तर्जनीभ्यां ० उच्छिष्टचांडालि मध्यमाभ्यां
नमः ॥ श्रीमातंगेश्वरि अनामिकाभ्यां ० सर्वजनवशंकरि कनि
ष्ठिकाभ्यां ० स्वाहा करतलकरपृष्ठाभ्यां ० इति करन्यासः ॥ ॐ
ह्रीं ऐं श्रीं हृदयाय ० नमो भगवती शिरसे स्वाहा ॥ उच्छिष्टचांडा
लि शिखायै वषट् ॥ श्रीमातंगेश्वरि कवचाय हुं ॥ सर्वजनवशं
करि नेत्रत्रयाय वौषट् ॥ स्वाहा अस्त्राय फट् ॥ इति हृदयादिन्यासः ॥
अथ ध्यानं ॥ घनश्यामलांगीं स्थितां रत्नपीठे शुकस्योदितं शृण्वतीं

कवस्त्रां॥ सुरापानमत्तां सरोजस्फुरितां॥ घ्रिं रक्तवेवद्दनकीवाद
यंतीमतंगीं॥ इति ध्यात्वा मनसा संपूज्य॥ ॐ ह्रीं ऐं श्रीं नमो
भगवति उच्छिष्टचांडालि श्रीमातंगेश्वरि सर्वजनवशंकरि
स्वाहा॥ इति यथाशक्ति मूलं जपेत्॥ तद्दशजपः पुरश्चरणं॥
सुमुखिराजमातंगेश्वरीमालामंत्रप्रत्नय एतस्या एवनि
त्येयाः॥ ८॥ अथ कमलाविद्या॥ ॐ अस्य श्रीकमलामहाल
क्ष्मीमंत्रस्य दक्षऋषिः॥ विराट्छंदः॥ श्रीमहालक्ष्मीः कमला
देवता श्रीं बीजं ह्रीं शक्तिः॥ मम श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे
जपे विनियोगः इति संकल्प्य॥ ॐ दक्षाय ऋषये॰ शिरसि॥ वि
राट्छंदसे॰ मुखे॥ श्रीमहालक्ष्मीदेवतायै हृदये॥ श्रीं बीजा
य॰ गुह्ये॥ ह्रीं शक्तये॰ पादयोः॥ मूलं सर्वांगे [illegible]॥ न्यासः॥ ८

ॐ श्रीं ह्रीं श्रीं कमले ॐ श्रीं ह्रीं श्रीं अंगुष्ठाभ्यां॰ ॐ श्रीं ह्रीं श्रीं कम
लालये ॐ श्रीं ह्रीं श्रीं तर्जनीभ्यां॰ ॐ श्रीं ह्रीं श्रीं प्रसीद ॐ श्रीं ह्रीं श्रीं
मध्यमाभ्यां॰ ॐ श्रीं ह्रीं श्रीं प्रसीद ॐ श्रीं ह्रीं श्रीं अनामिकाभ्यां॰
ॐ श्रीं ह्रीं श्रीं महालक्ष्मि ॐ श्रीं ह्रीं श्रीं कनिष्ठिकाभ्यां॰ इति कर
न्यासः॥ ॐ श्रीं ह्रीं श्रीं कमले ॐ श्रीं ह्रीं श्रीं हृदयाय॰ ॐ श्रीं ह्रीं श्रीं
कमलालये ॐ श्रीं ह्रीं श्रीं शिरसे स्वाहा॥ ॐ श्रीं ह्रीं श्रीं प्रसीद ॐ
श्रीं ह्रीं श्रीं शिखायै वषट्॥ ॐ श्रीं ह्रीं श्रीं प्रसीद ॐ श्रीं ह्रीं श्रीं कव
चाय हुं॥ ॐ श्रीं ह्रीं श्रीं महालक्ष्मि ॐ श्रीं ह्रीं श्रीं अस्त्राय फट्॥
अथ ध्यानं॥ सिंदूराभ एं कांतिमब्ज वसंतिं सोद्यपवांतांतिधि
कोटीरांगदहारकुंडलकटीसूत्रादि विभूषितां॥ हस्ताब्जैर्वसु
पात्रमब्जयुगलादर्शौ वहंतीपरा माबीतांपरिचारिकाभिरनिशंध्या

येन्त्रियांशाऽङ्कुशः॥इतिध्यात्वामनसासंपूज्य॥ॐश्रींह्रींश्रीं
कमलेकमलालयेप्रसीदप्रसीदश्रींह्रींश्रींॐमहालक्ष्म्यै॰
इतियथाशक्तिमूलमंत्रंजपेत्॥तद्जपःपुरश्चरणे॥त्रित
धुराक्तैर्बिल्वफलैस्तद्दशांशतोहोमात्सिद्ध्यतिमंत्रः॥एवंक
मेणदशमहाविद्यानुकृताः॥ताश्चश्रीविद्योपासकैःश्रीमदाचा
र्यमुखतोऽवगंतास्त्रिच्छिष्येभ्योदेयाः॥स्वयंजप्तव्या॥ ॥इति
दशमहाविद्याक्रमः॥ ॥छ॥ ॥छ॥ ॥छ॥ ॥छ॥ ॥छ॥
संवत्१८८०नाआश्विनवद७गुरौलिखितंॐरपाऽमध्येश्री
सूर्यपुरवास्तव्यआभ्यंतरनागरज्ञातीयद्विवेदीरामलक्ष्म
सुतलक्ष्मीदेवेनपरोपकारार्थंचलिखितं॥शुभमस्तु॥छ॥ ९